M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref. / Ser. 1238

Title : Amnayakrama

1238

InComplete

C ya

Anukrama ^			Title
			Author
			Editor
Sk			Year, Vols.
			Publisher
1238		Pages 46 8	Remarks

श्रीः अथाम्नायक्रमः ॐ अस्यश्रीशुद्धविद्यामहामंत्रस्य कर्मविपाकऋ
षिः गायत्रीछंदः शुद्धविद्यादिव्यमनोन्मनादिनीदेवता ऐंबीजं ईंशक्तिः
औंकीलकं ममपशुत्वमोचनद्वाराशुद्धविद्याप्रसादसिध्यर्थेजपेविनियोगः
पूर्ववदृष्यादिन्यस्य अथकरन्यासः ॐ ऐं क्लीं श्रीं ऐं अंगु० ४ ईं तर्जनी०
४ औं मध्य० ४ औं अनामि० ४ ईं कनिष्ठि० ४ ऐं करतल० एवंहृदया
दिन्यासः ४ भूर्भुवस्वरोमितिदिग्बंधः अथध्यानं महदपिमहमान्ये
मातृकादिव्यरूपेसदसद्भयरूपेसर्वतंत्रप्रकाशे हसकलहहहरूपेकुंड
लीस्फुर्तिरूपेप्रणतमेजनमवाग्नीआलिकेशुद्धविद्ये स्तंभनमुद्रादि
कुंडलंमुद्रांतंप्रदर्श्यमानसपंचोपचारैः संपूज्यसर्वमंत्रादौतारचतुष्ट

पू॰ म्ना॰ यंयोजयेत् अथमनुः ४ ऐंईंऔः औः ईंऐं ईं ॐ अस्यश्रीबालात्रिपुरसुंद
४ रीमहामंत्रस्य दक्षिणामूर्त्तिऋषयेनमः शिरसि पंक्तिछंदसेनमः मुखे श्री
बालात्रिपुरसुंदरीदेवतायैनमः हृदि ऐंबीजायनमः गुह्ये सौः शक्तयेनमः
पादयोः क्लींकीलकायनमः नाभौ श्रीबालात्रिपुरसुंदरीदेवता[illegible]नमः सर्वांगे
४ ऐंअंगुष्ठा॰ ४ क्लींतर्ज॰ ४ सौः मध्य॰ ४ सौः अनामि॰ ४ क्लींकनि॰ ४ ऐं
करतल॰ एवंहृदयादि ध्यानं अरुणकिरणजालैरंजितासावकाशा विधृत
जपवटिकापुस्तकाभीतिहस्ता इतरवरकराढ्या फुल्लकल्हारसंस्थानिवसतु
हृदि बालानित्यकल्याणशीला १ मानसैः संपूज्य स्तंभनादिपंचमुद्रांप्र
दर्श्य ऐंवरदमुद्रांप्र॰ क्लींअभयमुद्रां॰ सौः पुस्तकमुद्रां॰ सौः अक्षमा ४

लामुद्रांप्र॰ क्लींकिरीटमुद्रांप्र॰ ऐंमकरकुंडलमुद्रांप्र॰ एताः मुद्राः प्रदर्श्य ततः
मानसैः संपूज्य मनुः ४ हंसः ऐं क्लीं सौः सौः क्लीं ऐं सोहं १० ॐ अस्यश्री
द्वादशार्धांबामहामंत्रस्य आनंदभैरवऋषयेनमः शिरसि गायत्रीछंदसे॰
मुखे द्वादशार्धांबादेवतायै॰ हृदि ऐंबीजायनमः गुह्ये ईंशक्तयेनमः पाद
योः सौः कीलकाय॰ सर्वांगे द्वादशार्धांबाप्रसाद॰ ४ हसक्षमलवरयूं ह
सकलरडैं अंगुष्ठा॰ ४ हसक्षमलवरयूं हसकलरडीं तर्ज॰ ४ हसक्ष॰ हसक
थैं ३ लरडौः मध्यमा॰ ४ हसक्ष॰ हसकलरडौः अनामि॰ ४ हसक्ष॰ यौः हसक
लरडीं कनिष्ठि॰ ४ हसक्ष॰ यः हसकलरडैं करतल॰ एवंहृदयादि ध्यानं
तारेशोबालमौलिं त्रिनयनविलसत्पंचवक्त्रांशवस्त्रांरक्तांगीरक्तपंकाक

पू॰ म्ना॰ लितनरशिरोमालिकालंकृतांगीं देवीं सृण्यक्षमालाकुसुमशरवरेक्षुचापाहि
५ पाशंपुस्तकशूलकपालाभयकलितभुजोदिव्यरूपांनमामि ४ अंकुशमुद्रां॰ ४
अक्षमालमुद्रां॰ ४ पुष्पबाणमुद्रां॰ ४ वरदमुद्रां॰ ४ इक्षुबीशामुद्रां॰ ४ नागपा चापं
शमुद्रां॰ ४ पुस्तकमुद्रां॰ ४ शूलमुद्रां॰ ४ कपालमुद्रां॰ ४ अभयमुद्रां॰ ४ किरी
टमुद्रां॰ ४ मकरकुंडलमुद्रां॰ मानसैःसंपूज्य ४ ह्सकलरडींह्सकलरडौःह्स
कलरडौःह्सकलरडींह्सकलरड्ढैं॰ ३६ ॐ अस्यश्रीह्संतीमहामंत्रस्य
आनंदभैरवऋषयेनमः शिरसि त्रिष्टुपछंदसे॰ मुखे श्रीह्संतीदेवतायै॰
हृदये क्लींबीजा॰ गुह्ये ठःशक्तये॰ पादयोः स्वाहाकीलका॰ नाभौ श्री
ह्संतीदे॰ प्रसाद॰ करसंपुटे ऋामितिषडंगहृदयन्यासः ध्यानं आ ५

ह्सकलरडैं

गुल्फांतावलंबामरुणमणिनिभांकंचुकींधारयंतींकादंबर्याकषायैकृतनयनयुगां
कंदलंमंदहासा मेघश्यामामृगांकोल्लसितकबरिकापाणिपद्मांत्रिनेत्रांमातंगे
ष्टाह्संतीममभवतुसदामंत्रविघ्नप्रशांतै ध्यानोक्तमुद्रांप्रदर्श्यमानसैःसंपूज्य
४ ह्संतीह्सितालापमातंगीपरिचारके भयविघ्नपदांनाशंकुरु२ ठःठः हुंफट्
स्वाहा ३८ अस्यश्रीराजमातंगेश्वरीमहामंत्रस्य महामतंगऋषये॰
शिरसि पंक्तीछंदसे॰ मुखे श्रीराजमातंगेश्वरीदेवतायै॰ हृदि क्लींबी
जाय॰ गुह्ये क्लींशक्तये॰ पादयोः श्रींकीलकाय॰ सर्वांगे श्रीराजमा
तंगीश्वरीप्रसादः॰ ॐ नमोभगवतिराजमातंगेश्वरीअंगुष्ठा॰ सर्वज
नमनोहारीसर्वमुखरांजिनीतर्ज॰ क्लींह्रींश्रींसर्वराजवशंकरिसर्वस्त्रीपु

पृ॰ म्मा॰ रुषवशंकरिमध्यमा॰ सर्वदुष्टमृगवशंकरीसर्वसत्ववशंकरीअनामिका॰
६ सर्वलोकवशंकरीसर्वजनंमेवशमानयकनिष्ठि॰ स्वाहाकरतल॰ एवंहृदय॰
ध्यानं ध्यायेयंरत्नपीठेशुककलपठितंशृण्वतींश्यामगात्रांन्यस्तैकांघ्रिंसरो
जेशशिशकलधरांवल्लकींवादयंतीं कल्हारावद्धमालांदूतरकरलसच्चू
लिकांरक्तवस्त्रां कर्णोद्याशंखपत्रांमधुमदविवशांचित्रकांतांमतंगीं
श्रींशूलिकामुद्रां॰ ४ क्लींवल्लकीमुद्रां॰ ४ क्लींशुकमुद्रां॰ ४ कीरीटमु॰
४ मकरकुंडलमु॰ ४ योनिमुद्रां॰ मानसैःसंपूज्य ४ ऐं क्लींसौः ॐनमो
भगवतिराजमातंगेश्वरीसर्वजनमनोहारिसर्वमुखरंजिनी क्लींह्रींश्रीं
सर्वराजवशंकरिसर्वस्त्रीपुरुषवशंकरिसर्वदुष्टमृगवशंकरिसर्वस ६

त्ववशंकरिसर्वलोकवशंकरिसर्वजनंमेवशमानयस्वाहाश्रींह्रींक्लीं ११ एकनव
त्यक्षरीविद्या अस्यश्रीशुकश्यामलामहामंत्रस्य शुकऋषये॰ शिरसि पंक्ती
छंदसे॰ श्रीशुकश्यामलांबादेवतायै॰ हृदये ऐंबीजा॰ क्लींशक्तये॰ पादयोः सौः
कीलकाय॰ सर्वांगे श्रीशुकश्यामलांबाप्र॰ श्रीमितिहृद्यन्यासः ध्यानं निगम
सहकारमूलेनिर्मलकोलालुवालवलयांते प्रतिफलितागमशाखेफलरसिकोयंः
शुकोस्तुमसभूत्यै मुद्रांप्रदर्श्यमानसैःसंपूज्य ॐनमोभगवतेमहाशुकायत्रिभु
वनवशंकरायराजमदमर्दनायशीघ्रंराजानंमेवशमानयस्वाहा ४२ द्वात्रिंश
दक्षरमंत्रोयं अस्यश्रीशारिकामहामंत्रस्य शौनकऋषये॰ शिरसि अति
जगतीछंदसेन॰ मुखे श्रीशारिकाश्यामलांबादेवतायै॰ हृदये ऐंबीजाय॰

पू॰म्ना॰

गुह्ये क्लींशक्तये॰ पादयोः सौःशक्तये॰ सर्वांगे श्रीशारिकांबाप्रसाद॰ श्यामिति
न्यासः श्यामाकरांभोरुहकेलिलोलांपारावतंसाश्रितपाणिपद्मां पद्यातिहृद्यांवि
शदामुपासेशारींचतुःषष्टिकलास्वरूपां मुद्रांप्रदर्श्यमानसैःसंपूज्य ॐनमोभगव
तिमहाशारिकेसकलकलाकोविदेएह्येहिदेवींबोधय २ स्वाहा २३ अस्यश्रीवे
णुश्यामलामहामंत्रस्य ईश्वरऋषये॰ शिरसि गायत्रीछंदसे॰ मुखे श्रीवेणु
श्यामलांबादेव॰ हृदि ऐंबीजाय॰ गुह्ये सौःशक्तये॰ पादयोः क्लींकीलका
य॰ सर्वांगे श्रीवेणुश्यामलांबादेवताप्र॰ यामितिषडंगः ध्यानं वक्त्रसौ
रभवशीकृतरंध्रे वस्तुनापटुतरेर्वयतेन गानदोखिलकलाकलनाद्रोमानदोभ
वतुमेमणिवेणुः मुद्रां॰ मानसपूजां॰ ॐनमोभगवतिमुरलीदेवीममसाहि ६

त्यविद्यांप्रयच्छस्वाहा २४ अस्यश्रीवेणाश्यामलामहामंत्रस्य ईश्व
रऋषये॰ गायत्रीछंदसे॰ मुखे वेणाश्यामलांबादेवता॰ हृदि ऐंबीजाय॰
गुह्ये सौःशक्तये॰ पादयोः क्लींशक्तये॰ सर्वांगे वेणाश्यामलांबाप्र॰ यांइ
तिषडंगः वक्त्रसौरभवशीकृतरंध्रे॰ ध्यानंमुद्रांमानसपूजांकृत्वा ॐनमो
भगवतिविवेणायैनमः संगीतविद्यांमेप्रयच्छस्वाहा २४ अस्यश्रीलघु
श्यामलांबामहामंत्रस्य मतंगानंदभैरवऋषये॰ शिरसि पंक्तिछंदसे॰ मुखे
लघुश्यामलांबादेवता॰ हृदि ऐंबीजाय॰ गुह्ये स्वाहाशक्तये॰ पादयोः सर्व
वशंकरीतिकीलकाय॰ सर्वांगे श्रीलघुश्यामलांबादेवताप्र॰ ऐंअंगुष्ठा॰
नमःतर्ज॰ उच्छिष्टचांडालीमध्य॰ मातंगीअना॰ सर्ववशंकरीकनिष्ठि॰

पु॰ स्ना॰ स्वाहा करतलपृष्ठा॰ एवंहृद॰ ध्यानं स्मरेत्प्रथमपुष्पिणींरुधिरबिंदुशोणां
८ बरां गृहीतमधुपात्रिकांमदविघूर्णनेत्रेछदां घनस्तनभरालसांगलितचू
लिकांश्यामलां करस्फुरितचषककीर्तिविमलतराविवलाट कांती ध्यात्वामुद्रामान
सपूजांकृत्वा मनुः ४ ऐंनमः उच्छिष्टचांडालिमातंगीसर्ववशंकरीस्वाहा
२० एताः चतस्त्रः कामगिरिपीठस्थाः प्रधानदेवताः ॐश्रीनाथमहामंत्र
स्य ब्रह्माऋषिः गायत्रीछंदः श्रीहंसरूपीश्रीगुरुनाथोदेवता हंबीजं
सःशक्तिः सोहंकीलकं श्रीहंसरूपीश्रीगुरुनाथप्रसाद॰ हंसांद्युनिष
डंगन्यासः ध्यानं वंदेगुरुपदद्वंद्वमवाङ्मनसगोचरं रक्तशुक्लप्रभामिश्र
मतर्क्यंत्रैपुरंमहः ध्यात्वामुद्रांमानसपूजांकृत्वा ४ हंसः शिवः सोहं हं ८